DPN 5429

Title : आदित्य हृदय ĀDITYA HṚDAYA

Run. No. 6120 Cat. No. 81 Micro. No.

Subject स्तोत्र Hymn Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 25.5 × 10.3 Folios 2–9 ~~8–9~~ Lines (in a page) 9

Compl. / Incompl. Chapt. / act / Begining and ~~last~~ folia missing

[illegible] पौ ५६।

Author / translator Scribe / donor

Date: NS / SS / VS / KS Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu / Oneside yellow

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

CENTIMETERS

सर्वरोगोपशमनमायुर्वर्द्धनमुत्तमं ॥ अमित्रदमनं पार्थ संग्रामे जयवर्द्धनं ॥ वर्द्धनं धनपु:
त्राणामादित्यहृदयं शृणु ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ त्रिषु लोकेषु विख्यातं
निःश्रेयसकलं परं ॥ देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन ॥ तस्मात्सर्वप्रयत्नेन सूर्यमारा:
धयेत्सदा ॥ विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि ॥ आदित्यहृदयं नित्यं जाप्यन्तच्छृणु पाण्ड:
व ॥ ॥ ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य श्रीकृष्ण ऋषिः श्रीसूर्यनारायणो देवता अनु
ष्टुप्छन्दः हरितहयरथं दिवाकरं घृणिरिति बीजं ॐ नमो भगवते जितवैश्वानरजातवेदसे
नमः इति शक्तिः ॐ नमो आदित्याय इति कीलकं मम सकलकामप्राप्त्यर्थं जपे विनियोगः ॥ ॥
ॐ अर्कन्तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ॥ विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्च दिवाकरं ॥ ना:
सिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ॥ पर्जन्यमोष्ठयोश्चैव जिह्वौ तीक्ष्णकरं न्यसेत् ॥ सुवर्ण

आ॰ हृ॰

रत्नसंकुलैःस्कंधयोस्तीक्ष्णतेजसं॥बाह्वोस्तुपूषणंचैवमित्रंचैवतुपृष्ठतः॥वरुणंदक्षिणेह-
स्तेत्वष्टारंवामतःकरे॥हस्तांगुलंकरंपातुहृदयेतुगभस्तिमान्॥उदरंतुयमंविद्यादादित्यं
नाभिमंडले॥कट्यांतुविन्यसेद्धंसंरुद्रमूर्वोस्तुविन्यसेत्॥जान्वोर्गोपतिंन्यस्यसवितारंतुजंघ-
योः॥पादयोस्तुविवस्वंतंगुल्फयोश्चदिवाकरं॥बाह्यतस्तुतमोध्वंसंभगमभ्यंतरेन्यसेत्॥स-
र्वांगेषुसहस्रांशुंदिग्विदिक्षुभयंन्यसेत्॥एवमादित्यविन्यासोदेवानामपिदुर्लभः॥इमंभ-
क्त्यान्यसेत्पार्थसयातिपरमांगतिं॥कामक्रोधकृतात्पापान्मुच्यतेनात्रसंशयः॥सर्पादपिभ-
यंनैवसंग्रामेचपथिष्वपि॥रिपुसंघट्टकालेचतथाचोरसमागमे॥त्रिसंध्यंजपतोन्यासंम-
हापातकनाशनं॥विस्फोटकसमुत्पन्नंतीव्रज्वरसमुद्भवं॥शिरोरोगंनेत्ररोगंसर्वव्याधिविना-
शनं॥कुष्ठव्याधिस्तथादद्रुरोगाश्चविविधास्तथा॥जपतःस्नपनश्यंतिभक्त्याशृणुतदर्जुन॥

राम॰ २

आदित्यंमंत्रसंयुक्तमादित्यंभुवनेश्वरं॥आदित्यान्नापरोदेवआदित्यःपरमेश्वरः॥आदित्यम-
र्चयेद्ब्रह्माआदित्यमर्चयेच्छिवः॥यदादित्यमयंतेजोममतेजस्तदर्जुन॥आदित्यःपश्यतेये-
ननेतेपश्यंतिमानवाः॥त्रिसंध्यमर्चयेत्सूर्यमर्चयेद्यःपरंनरं॥दारिद्र्यंनैवपश्यन्तिसप्तजन्
मसुपार्थिव॥त्रिगुणंतुत्रयोमन्त्रास्त्रयोवेदास्त्रयोग्नयः॥प्रणवस्त्वंतुयःसूर्यस्तुरीयस्तुन-
मोनमः॥अजायलोकत्रयभावनायसर्वात्मनेगोपतयेवृषाय॥सूर्यायसर्गप्रलयोद्भवाय
नमोमहाकारुणिकोत्तमाय॥एतत्तेकथितंपार्थआदित्यहृदयंमया॥यच्छ्रुत्वामुच्यतेपापैः
सूर्यलोकंसगच्छति॥आदित्यःसवितासूर्यःखगःपूषागभस्तिमान्॥सुवर्णःस्फटिकोभानुःस्फुर-
तोविश्वतापनः॥हिरण्यगर्भस्त्रिशिराःसर्वदोभास्करोरविः॥मार्तंडोगोपतिःश्रीमान्कृतज्ञश्च
प्रतापवान्॥तमिस्रहाभगोहंसोनासत्यश्चतमोनुदः॥शुद्धोविरोचनःकेशीसहस्रांशुर्महाप्रभुः

आ॰ ६

विवस्वान्सुषणो मृत्युर्मिहिरो नित्यप्रतापवान्॥ धर्मरश्मिः पतंगश्च शरण्यो मित्रहा तपाः॥ दुर्वि
ज्ञेयगतिः शूरस्तेजोराशिर्महायशाः॥ शंभुश्चित्रांगदो सौम्यो हव्यकव्यप्रदायकः॥ अंशुमानुत्त
मोदेवो ऋग्यजुःसाम एव च॥ हरिदश्वः कर्मसाक्षी सप्तसप्तिर्मरीचिमान्॥ अग्निगर्भोदितेः पुत्र
शंभुस्तिमिरनाशनः॥ पूषा विश्वंभरो मित्रः सुवर्णः सुप्रदीपकः॥ धनापी मण्डली भानुस्तपनो
विश्वतापनः॥ कृतविश्वो महातेजाः सर्वरत्नमयोद्भवः॥ अक्षरश्चाक्षरश्चैव प्रभाकरदिवाकरौ॥ रामः
वंदवत्नांगदः सोम्यो हव्यकव्यफलप्रदः॥ अंगारकोंगदोगस्त्यो रक्तांगश्चांगवर्द्धनः॥ बुधोबु
द्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्द्धनः॥ बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः॥ शुक्रस्त्वशुक्ररेताश्च ३
शुक्रांगः शुक्रभूषणः॥ शनिमान्शनिरूपस्तु शनिर्गच्छति सर्वदा॥ अनादिरादिरूपस्तु आदित्यो
दिग्पतिर्यमः॥ भानुमान्भानुरूपस्तु स्वर्भानुर्भानुदीप्तिमान्॥ धूमकेतुर्महाकेतुः सर्वकेतुरनुः

स्यो ४

अनादिरादिरादित्य. तेजोराशिर्महातपाः॥२

मि२ दिवाकराय मित्राय दिक्कालाय नमो नमः॥ नमो नमस्सहस्रांशो आदित्याय नमो नमः २

नमः॥ तिमिराक्रान्तः शंभुस्त्वष्टा मार्तण्ड एव च॥ नमः पूर्वाय गिरये पश्चिमाय नमो नमः॥ नमो
त्तराय गिरये दक्षिणाय नमो नमः॥ नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने॥ नमो नमः सहस्रां
शो आदित्याय नमो नमः॥ नमो विश्वप्रबोधाय नमो भ्राजिष्णु विष्णवे॥ ज्योतिषे च नमस्तुभ्यं ज्ञाना
र्काय नमो नमः॥ प्रदीप्ताय प्रगल्भाय युगान्ताय नमो नमः॥ नमोंकार वषट्कार सर्वयज्ञ नमोन
मः॥ ऋग्वेदादि यजुर्वेद सामवेद नमोस्तु ते॥ नमो हाटकवर्णाय भास्कराय नमोस्तु ते॥ जयाय
जयरुद्राय हरिदश्वाय ते नमः॥ दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः॥ नमस्त्रैलोक्यना
थाय भूतानां पतये नमः॥ नमस्ते शुचये नित्यं सर्वकृतु फलात्मने॥ नमो वेकल्पनाज्ञाय नम
स्ते जगदात्मने॥ त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं प्रभुस्त्वं प्रजापतिः॥ त्वमेव रुद्रो रुद्रात्मा वायुरग्निः
त्वमेव हि॥ योजनानां सहस्रे द्वे द्वे शते द्वे च योजने॥ एकेन निमिषार्द्धेन क्रममाण नमोस्तु ते॥ अ॰

दिव्यचक्षुषे२ विष्णु२ नमस्ते हाटकपतये पृथिवीपतये नमः ६

इवि॰

आ॰हृ॰

यतश्चनमस्तुभ्यं ह्यष्टतश्चनमोनमः॥पार्श्वतश्चनमस्तुभ्यं नमस्तेचास्तुसर्वतः॥नमःसुरारिनाशा
यसोमसूर्याग्निचक्षुषे॥नमोवेदायव्योमायसर्वमंत्रमयायच॥अरुणोमाघमासेतुसूर्यो
वैफाल्गुणेतथा॥चैत्रमासेतुवेदाङ्गोभानुर्वैशाखतापनः॥ज्येष्ठमासेतपेदिंद्रआषाढेतपः
तेरविः॥गभस्तिश्रावणेमासियमोभाद्रपदेतथा॥हिरण्यरेतावाश्विन्यांकार्त्तिकेचदिवाकरः
मित्रोमार्गशिरेमासेपोषेविष्णुःसनातनः॥पुरुषोत्वमोमाघेमासेमासानांपरिकीर्त्यते॥इत्येतेद्वा
दशादित्याःकाश्यपेयाःप्रकीर्तिताः॥उग्ररूपामहात्मानस्तपन्तेविश्वरूपिणः॥धर्मार्थकाममोक्षा राम:
णामवश्यंहेतवोनृपः॥सर्वपापहरांश्चैवआदित्यान्यःप्रपूजयेत्॥एकेवादशधाचैवशान्त
थावसहस्रधा॥तपन्तिविश्वरूपेणसंहरन्तिसृजन्तिच॥एषविष्णुःशिवश्चैवब्रह्माचैवप्रजा ४
पतिः॥महेश्वरोमहेन्द्रश्चयमोवरुणएवच॥नक्षत्रग्रहताराणामधिपोविश्वतापनः॥वायुर

ग्निर्धनाध्यक्षोभूतकर्तास्वयंप्रभुः॥एषदेवोहिदेवानांसंहर्तारक्षकस्तथा॥एषलोकानुका
रश्चसप्तद्वीपाश्चसागराः॥एषपातालेलोकाश्चदैत्यदानवराक्षसाः॥एषधाताविधाताचवीः
र्यक्षेत्रंपरागतिः॥यश्चसर्वप्रजानित्यंसंवर्द्धयतिरश्मिभिः॥यश्चवषट्स्वधास्वाहाह्रींश्रीश्च
पुरुषोत्तमः॥सर्वदेवात्मकोदेवःसूक्ष्मोव्यक्तःसनातनः॥ईश्वरःसर्वभूतानांपरमेष्ठीप्रजापः
तिः॥कालात्मासर्वभूतात्मावेदात्मासर्वतोमुखः॥जन्ममृत्युजराव्याधिसंसारभयनाशनः॥दारि
द्र्यव्यसनध्वंसीश्रीमान्यातुदिवाकरः॥विकर्त्तनोविवस्वांश्चमार्त्तण्डोभास्करोरविः॥लोकप्रकाश
कःश्रीमान्लोकचक्षुर्महेश्वरः॥लोकसाक्षीत्रिलोकेशःकर्ताहर्तातमिस्रहा॥तपनःपावनश्चैव
शुचिःसप्ताश्ववाहनः॥गभस्तिहस्तोब्रह्मण्यःसर्वदेवनमस्कृतः॥आयुरारोग्यमैश्वर्यंधनवर्द्धनः
मन्दिरे॥यस्यप्रसादात्संतुष्टिरादित्यहृदयंपठेत्॥इत्येतेर्नामभिःप्राज्ञआदित्यस्तोतिनित्यशः

आ.हृ.

प्रातरुत्थायकौन्तेयनस्यरोगभयंकुतः॥पातकान्मुच्यतेपार्थव्याधिभ्यश्चनसंशयः॥एकसंध्यं
द्विसंध्यंवासर्वपापैःप्रमुच्यते॥त्रिसंध्यंजाप्यमानस्तुपश्येच्चपरमंपदं॥यद्दिवाकुरुतेपापंतद
हःप्रतिमुच्यते॥यद्रात्र्याकुरुतेपापंतद्रात्रौप्रतिमुच्यते॥दद्रुस्फोटककुष्ठानिमण्डलानिवि
चर्चिकाः॥एवमन्येदुष्टरोगाश्चक्षुतीसारादयोज्वराः॥जपमानस्यनश्यन्तिजीवेच्चशरदांशतं॥सं
वत्सरेणमरणंयदातस्यध्रुवंभवेत्॥अशीर्षांपश्यतिच्छायामहोरात्रेनसंशयः॥यस्त्विदंप्र
ठतेभक्त्यावारेभानोर्महात्मनः॥प्रातःस्नानेकृतेपार्थएकाग्रकृतमानसः॥सुवर्णचक्षुर्भवति
नवांधस्तुप्रजायते॥पुत्रवान्धनसंपन्नोजायतेनिरुजःसदा॥आदित्यहृदयंपुण्यंसूर्यनामः
विशेषितं॥कृत्वावानिखिलंपार्थसर्वपापैःप्रमुच्यते॥अतःपरतरंनास्तिसिद्धिकामस्यपाण्ड
व॥एतज्जपस्वकौन्तेययेनश्रेयोह्यवाप्स्यसि॥आदित्यहृदयंपुण्यंयःपठेत्सुसमाहितः॥ब्र

राम:
५

ह्महामुच्यतेपापात्कृतघ्नोगोघ्नएवच॥यइदंशृणुयान्नित्यंजपेद्वापिसमाहितः॥सर्वपाप
विमुक्तात्मासूर्यलोकेमहीयते॥अपुत्रोलभतेपुत्रान्कुजन्माजन्ममाप्नुयात्॥कुरोगीमुच्य
तेरोगाद्भक्त्यायःपठतेसदा॥यस्त्वादित्यदिनेपार्थनाभिमात्रोदकेस्थितः॥उदयाचलमारू
ढंभास्करंप्रणतःस्थितः॥जपतेमानसोभक्त्याशृणुयाद्वापिभक्तितः॥सयातिपरमंस्थानंयत्र
देवोदिवाकरः॥अमित्रदमनींपीडांयदाकर्तुंसमारभेत्॥तदाप्रतिकृतिंकुर्याच्छत्रोश्चसा
पांसुना॥आक्रम्यवामपादेनआदित्यहृदयंजपेत्॥ ॥ॐह्रिमालीस्वाहा॥ॐह्रिमालीठः
स्वाहा॥ॐनिलीठंस्वाहा॥ ॥त्रिभिश्चरोगीभवतिज्वरीभवतिपंचभिः॥जपैस्तुसप्तभिःपार्थरा
क्षसीस्तनुमाविशेत्॥राक्षसेनाभिभूतस्यविकारंछिणुपाण्डव॥गायतेनृत्यतेनग्नआस्फोटय
तिधावति॥शिवारुतंप्रकुरुतेक्रन्दतेचपुनःपुनः॥एवंसंपीडितेपार्थयद्यपिस्यान्महेश्वरः

आ॰ह॰

किंपुनर्मानुषः कश्चिक्कोचाचारविवर्जितः ॥ पीडितस्यत्न संदेहो ज्वरो भवति दारुणः ॥ यदा चा-
नुग्रहं तस्य कर्त्तुमिच्छेच्छुभंकरं ॥ तदा सलिलमादाय जपेन्मंत्रमेसदा बुधः ॥ ॐ नमो भगवते त-
स्मै आदित्याय नमो नमः ॥ जयाय जयभद्राय हरिदश्वाय ते नमः ॥ स्नापयेत्तेन मन्त्रेण शुभं
भवति नान्यथा ॥ अन्यथा त्वभवेद्दोषो पश्यंति नात्र संशयः ॥ सर्वस्तेनिखिलः प्रोक्तः पूजां चैव
निबोधमे ॥ उपलिप्य शुचौ देशे नियतो वाग्यतः शुचिः ॥ वृत्तं वा चतुरस्त्रं वा मण्डलं गोमयेन तु
अष्टपत्रं लिखेत्तस्य लिङ्गो मध्यमण्डले ॥ पूर्वपत्रे लिखेत्सूर्य्यमाग्नेयां तु रविं न्यसेत् ॥ याम्यां राम॰
वै चविवस्वंतं नैऋत्यां च भगं न्यसेत् ॥ वारु[illegible]वरुणं विद्याद्वायव्यां मित्रमेव च ॥ आदित्यमुत्त- ६
रे पत्रे ईशान्यां विष्णुमेव च ॥ मध्ये तु भास्करं विद्यात्क्रमेणैव तमर्चयेत ॥ ॐ नमो भगवते चक्र
मेणैव समर्चयेत् ॥ अतः परं प्रवक्ष्यामि इष्टिकामस्य भारत ॥ महातेजस मुग्रन्त्वं पुर्णो[illegible]रु-

स्यां३ न्यथा२ मृत

ताञ्जलिः ॥ सकेशराणि पद्मानि करवीराणि पाण्डव ॥ तिलतण्डुलसंयुक्तं कुशगंधोदकेन तु
रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने ॥ कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः ॥ मन्त्रपूतं
गुडाकेश दद्यादर्घ्यं गभस्तिने ॥ ॥ ॐ विश्वाहरि शुकदुश्कदेसर्वार्थसाधनी स्वाहा ॥ ॐ क्रांइं
क्रूंसः सूर्य्याय नमः ॥ ॐ क्रूं मार्त्तण्डाय स्वाहा ॥ ॐ क्रां खखखोल्काय सूर्य्यमूर्त्तये स्वाहा ॥ खखो-
काय सूर्य्याय स्वाहा ॥ ॥ नमोस्तु सूर्य्याय सहस्त्ररश्मये नमोस्तु वैश्वानरजातवेदसे ॥ त्वमे-
व चार्घ्यं प्रतिगृह्ण गृह्ण देवाधिदेवाय नमो नमस्ते ॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे ॥ द-
त्तमर्घ्यं मया भानो त्वं गृहाण नमोस्तु ते ॥ एहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते ॥ अनुकंपय
मां भक्त्या गृहाणार्घ्यं नमोस्तु ते ॥ ॥ ॐ नमो भगवते सूर्य्याय नमः ॥ अक्षय तेजसे नमः ॥ आदि-
त्याय नमः ॥ शिवाय नमः ॥ ॥ आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणं ॥ उभयोरन्तरं नास्ति

आ॰ह॰

आदित्यस्यशिवस्यच॥एतदिछाम्यहंकर्त्तुंपुरुषोवैदिवाकरे॥यत्रव्यालानवावन्तेव्याधि
भ्योनभयंक्वचित्॥इदयेब्रह्मरूपस्तुमध्याह्नेतुमहेश्वरः॥अस्तमानेस्वयंविष्णुस्त्रयीरूपीदि:
वाकरः॥नमोभगवतेतुभ्यंवैसर्वज्ञानवेदसे॥ममार्घ्यंप्रतिगृह्णत्वंदेवदेवनमोस्तुते॥हिम
घ्नायतमोघ्नायरक्षोघ्नायनमोनमः॥अकृतघ्नायदेवायतस्मैसूर्यात्मनेनमः॥हरितहयर
थंदिवाकरं॥ कनकमयांबुजरेणुपिञ्जलं॥प्रतिदिनमुदयेनवंनवं शरणमुपैमिहिरण्य:
रेतसं॥जयोजयश्चविजयोजितप्राणोजितश्रमः॥तमोजयोजितक्रोधोवाजिनःसप्तकीर्त्तिताः
नतत्रव्यालावावन्तेव्याधिभ्यश्चभयंनच॥नरोगेभ्योभयंचैवनचस्तेनभयंक्वचित्॥अग्निशत्रु
भयंनास्तिपार्थिवेभ्यस्तथैवच॥दुर्गतिंतरतेघोरांप्रजाश्चलभतेपशून्॥सिद्धिकामोलभेत्सि
द्धिंकन्याकामस्तुकन्यकां॥एतत्पठतिकौन्तेयभक्तियुक्तेनचेतसा॥अश्वमेधसहस्रस्यवाज

रामः
७

पेयशतानिच॥कन्याकोटिसहस्रस्यदत्तस्यफलमाप्नुयात्॥इदमादित्यहृदयंयोधीतेसम्य
कंनरः॥सर्वपापविशुद्धात्मासूर्यलोकेमहीयते॥नास्त्यादित्यसमोदेवोनास्त्यादित्यसमाग:
तिः॥प्रत्यक्षोभगवान्विष्णुर्येनविश्वंप्रतिष्ठितं॥गवांशतसहस्रस्यसम्यग्दत्तेनयत्फलं॥तत्फ
लंलभतेनित्यंशांतात्मास्तौतियोरविं॥योधीतेसूर्यहृदयंसकलंसुलभंवेत्॥अष्टानांब्राह्म
णानांचलिखित्वाचसमर्पयेत्॥ब्रह्मलोकेऋषीणांचपूज्यतेमानुषेष्वपि॥जायतेमानुषेष्वपि
जातिस्मरणमाप्नुयात्॥अजायलोकत्रयपावनायसर्वात्मनेगोपतयेवृषाय॥सूर्यायसर्व:
प्रलयान्तकायनमोमहाकारुणिकोत्तमाय॥विवस्वतेज्ञानभृतान्तरात्मने जगत्प्रदीपायज:
गद्धितैषिणे॥स्वयंभुवेदीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसेनमः॥सुरैरनेकैःपरिसे:
विताय हिरण्यगर्भायहिरण्मयाय॥महात्मनेमोक्षप्रदायनित्यं नमोस्तुतेवासरकारणाय॥

आ॰छ

सूर्य॰ २

आदित्यस्य विनो देवेरादित्यः परमं पदं ॥ आदित्यो मातृको भूत्वा बादित्यो वा ह्ययं जगत् ॥ आदित्यं पश्यते भक्त्या सेनो पश्यति मान्नरः ॥ ब्रह्मा विष्णुश्च रुद्रश्च तुरीयं च नमोस्तु ते ॥ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ॥ त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ यस्योदयेनेह जगत्प्रबुध्यते प्रवर्त्तते चाखिलकर्मसिद्धये ॥ ब्रह्मेन्द्रनारायणरुद्रवन्दितः स नः सदा यच्छतु मङ्गलं रविः ॥ नमोस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसंभवात्मने ॥ सहस्रयोगोद्भवभावभाजिने सहस्रसंख्यायुगधारिणे नमः ॥ यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपं ॥ दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यं ॥ यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतिर्भावनमुक्तिकोविदं ॥ तन्देवदेवं प्रणमामि सर्वदा पुनातु० ॥ यन्मण्डलं ज्ञानमयं च अगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपं ॥ समस्ततेजोमयदिव्यरूपिणं पुनातु०

रामः
८

सू॰ ३   हरिकृष्ण॰ नं ४   पक्ष ४

॰यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुःसामसु संप्रगीतं ॥ प्रकाशितं येन च भूर्भुवः स्वः पुनातु० ॥ यन्मण्डलं वेदविदो वदन्ति गायन्ति यन्मत्र्यसुरसिद्धयक्षाः ॥ यद्योगिनो योगयुजां विभक्ताः पुनातु० ॥ यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ॥ यत्कालकालादिमनादिमेनं दिव्यरूपं पुनातु० ॥ यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं दक्षं ॥ यत्केसकं ल्यसंक्षयकारणं च पुनातु० ॥ यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयं प्रसिद्धं ॥ यस्मिन् जगत्संहरतेखिलं च पुनातु० ॥ यन्मण्डलं सर्वगतस्य विष्णो रात्मा परं धाम विशुद्धतत्त्वं ॥ सूक्ष्मान्तरे योगरतेः प्रसिद्धं पुनातु० ॥ यन्मण्डलं वेदविदो वदंति गायन्ति यच्चारणसिद्धसंघाः ॥ यन्मण्डलं त्रिगुणा मंत्रविदः स्मरन्ति पुनातु० ॥ यन्मण्डलं ब्रह्मविदोपगीतं यद्योगिनां योगपथानुगम्यं ॥ तं सर्ववेदं प्रणमामि सर्वदा पुनातु मां तत्सवितुर्वरेण्यं ॥ मण्डलाष्टकमिदं पुण्यं यः पठेत्सततं नरः ॥ सर्वपा

मन्मगुलं मस्ठमतिप्रबोधं धर्मस्य वृद्धिं
को दु तेजनानां । तत्सर्वपापक्षयकारणं
वे पुनातु मां ०॥

ग॰ सं ५

कुशेशयाक्रान्तमनन्तमच्युतं॥ भजामिबुध्यातपनीयहृपिरां॥

आ॰ हृ॰

पविशुद्धात्मा सूर्यलोके महीयते॥ ध्येयः सदा सवितृमण्डलमध्यवर्त्ती· नारायणः सरसिजा
सनसन्निविष्टः॥ केयूरवान्मकरकुण्डलवान्किरीटी· हारीहिरण्मयवपुर्धृतशंखचक्रः॥ शं
खचक्रकरं विमण्डलस्थितं· सुरोत्तमं चित्रविभूषणोज्ज्वलं॥ वेदवेदाङ्गशारीरं दिव्यदीप्तिकरं
परं॥ रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकं॥ लोकप्रभाकरश्चैव लोकचक्षुर्महेश्वरः॥ तपनस्त
पनश्चैव शुचिः सप्ताश्ववाहनः॥ एकचक्ररथो यस्य दिव्यं कनकभूषितं॥ स मे भवतु सुप्रीतः
पद्महस्तो दिवाकरः॥ आदित्यं प्रथमं नाम द्वितीयं तु दिवाकरं॥ तृतीयं भास्करं प्रोक्तं चतुर्थं तु
प्रभाकरं॥ पंचमं तु सहस्रांशुं षष्ठं त्रैलोक्यलोचनं॥ सप्तमं हरिदश्वं च अष्टमं चाहःपतिं॥ नव
मं दिनकरः प्रोक्तं दशमं सूर्यमेव च॥ एकादशं त्रिमूर्त्तिश्च द्वादशं त्रिदशात्मकं॥ द्वादशैतानि
नामानि प्रातःकाले च यः पठेत्॥ दुःस्वप्ननश्यते तस्य सर्वदुःखं च नश्यति॥ दद्रुकुष्ठहरं चैव स

राम॰
३